This PDF you are browsing now is a digitized copy of rare books and manuscripts from the Jnanayogi Dr. Shrikant Jichkar Knowledge Resource Center Library located in Kavikulaguru Kalidas Sanskrit University Ramtek, Maharashtra.

KKSU University (1997- Present) in Ramtek, Maharashtra is an institution dedicated to the advanced learning of Sanskrit.
The University Collection is offered freely to the Community of Scholars with the intent to promote Sanskrit Learning.

Website
https://kksu.co.in/

Digitization was executed by NMM

https://www.namami.gov.in/

Sincerely,

Prof. Shrinivasa Varkhedi
Hon'ble Vice-Chancellor

Dr. Deepak Kapade
Librarian

Digital Uploaded by eGangotri Digital Preservation Trust, New Delhi
https://egangotri.wordpress.com/

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

॥श्रीखानखानाक्षितिपतिरखर्विशास्तिकल्याणानः किं॥यस्योद्यत्खड्गधारादलितरिपु
॥वृन्दकच्चयःश्रसृरिस्फारीभूतप्रवाहाप्स्विरमिहजलधेःसंगसोख्यमज्ञाम॥३॥श्रीखा
॥नखानाक्षितिपप्रतीतान्यैवसच्यान्नवतःप्रतिज्ञा॥त्वन्ननमेकत्रसुधाप्रतिज्ञःप्रतिश्रुता
॥दप्यधिकप्रदाने॥४॥प्रतापस्तेवह्निस्तदनुमितिहेतुःप्रतिनयाऽयशास्तोमोधूमःप्रसरति
॥नबाबक्षितिपते॥यतःशत्रुश्रेणीहरिणनयनामंडलदशामजस्रंबाष्पांबुप्रसरविरलिनैव
॥भवति॥५॥ ॥नबाबनृपमंडनत्वयिकृतप्रयाणोद्यमे किमद्भुतमितस्ततःक्षितिपमंडलीलि
॥यते॥नवकेटकघोटकस्फुरदखुरत्रुटद्भूरटद्रजस्ततिष्ठतीयतेदिनकरोपियत्कानन॥६॥
॥श्रीमद्वीरनबाबसैंधवखुरक्षुण्णांक्षितिंमूर्छितासर्वांद्यप्रतिनृपतिप्रियतमाःसिंचंतिनेत्रा
॥बुभिःलीलाकंपितकर्णतालपवनैःसंवीजयंतिद्विपाज्ञानीमोदिविधूमधिधाराणिरिपंकायार्थमुत्सर्पति॥

Acc. No. ~~582~~ M1480
Title - नबाबखानखानाचरित (उल्लास I-II) (अपूर्ण)
Author - रुद्रकवीन्द्र
Date - ?
Subject - इतिहास
folio - 22-20 (2 आणि 12 गहाळ)
Xerox - 40

KKSU LIBRARY RAMTEK 441 106 M.1480 Dist. Nagpur

Checked 2012

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

श्रुविरसित्वंधर्मराजोप्यसि॥राजन्नपुण्यजनोसिविश्वजनताधा
रञ्चेताजैत्राण[illegible]सिंधनेनोमदेश्वरइदश्रीखानखानज्ञभो
११॥ जयतिभुजबळविजितनमदरिवळसामंतमेदिनीरमणमुकु
टतटघटितमणिगणकिरणराजिनीराजितचरणकमलः कलिमळ
विदळनकुशलविमलविचित्रचरित्रपवित्रीकृतधरित्रीवलयः क
मलासनदिनसाध्वनवबळप्रतापतपनप्रकाशितत्रिभुवनः श
रदिंदुकरनिकरसुंदरकीर्तिसुधाधवलितसुरनरपन्नगसदनः
स्वच्छावतोलिन्नाधिकरणकमळासरस्वतीसख्यसिद्धाश्रमः।

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

सकल ळ नरपति कुळमौलि मालायितशासनः पाकशासन इव
सर्वैश्वर्यसंपन्नः सर्वपर्वत इव मित्रमंडळस्य प्रचंड दोर्दंडतांडवित कोदं
डमंडळ निस्सरदुद्दंडकांडखंडितप्रतिभट पुरंदर सुंदरी नय
ननीलोत्पळगळद्विरळजळभरपूरणकुतूहलसंजनितमुनिनिरंतं
क्ली न सकलजलधिवेळानिखातकीर्तिस्तंभभूषितब्रह्मांड
भवनः प्रविलसदनवरतवितरण वारिपूरपूर्णतो नतरंगिणी
निकरप्रवाहप्रतिवनप्रचारनदीमातृकीकृतक्षितिमंडळः स्वगुण
नियंत्रानिरस्तगुणायत्ताकल्पप्रसादः समरसमागतप्रतिभटमहा

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

रथमहीपतिवरसुरवधूविवाहकुतूहळघटकाराळकरवाळस
हायनिजभुजबळविजितांगतिलिंगकलिंगकुरंगजौगाळमगध
हज्जगुर्जरमाळवमळयकेरळकेकयकोशाळचोबंगाळपंचाळनेपा
[illegible]ळचोळकुंतळोत्कळयल्लुसिंधलपंपाळबाल्हीकजालंधर
बहलप्रालिंदकलिंदमेकलतामलल्लोहपत्तनेतल्लुकुंकण
लाटकर्णाटखंजरीटमोडगोंडवोडपांडुपौंड्रद्रविडसीकट
सौराष्ट्रपांच्यकांच्यराढवराटकच्छातटगौतमीतटनर्मदात

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

र तापीतट भोजकं बोध पारसीकं सुह्म हूण सूर सेन सिंधु मग
ध निषध कौशिकाश्मीर कीर सौवीर [illegible] हम्मीर लाहूर वैदर्भ शाकं
भ [illegible]री शक कामरूप कुरु ब्रह्म रल्ल ऋथकैशिक [illegible] कुरु घ्राणका
[illegible]क्षक वीकेकछ खस कन्यकुब्ज घर्जर बर्बरार्बुद मरुहिमाचळा
रूप [illegible] नीप दक्षिणापथोत्तरापथ तीरहोत्र वाम लिंग मैथिळ म
लव वाळा [illegible] जिवाजिका ज्ञान पारियात्र मध्यां [illegible] चौदं कोळं जर
स्त्रीराज्याद्यनेकदेश दुर्ग दुर्गमे ति रूपम महिमा [illegible] बर पूरित
[illegible] लांड [illegible] डोदरः॥ प्रबळ मणि [illegible] कंकण झण कार बोधित

ण२

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

पंचबाण हरिण नयनाकरकमळां दोलितकनकदंड मंडितचारुचा
मरचंद्रिकोद्यद्विगुणितवदनसुधाकरमंडकरामणीयकः॥ कर्ण
ताळताडितकपोळतंळमिळ दळिकुळ कळकळवाचाळ दंतावळमं
डळगळदविरल मदजळ जाळजंबालितसभासदनांगनानेक
द्वीपागतभूपाळमौलिमाणिक्यनिकरैर्निर्मलितचरणनखदर्पणं
करालनिजकरवालहिमालयशिखरावतीर्णकीर्तिसुरतरंगिणीप्र
वाह प्रतिवीरकृपाणकलिंदगिरिशिखरावतीर्णकीर्तिकालिंदी[illegible]सं
गमजुण्यरणांगणप्रयागकृतविग्रहविपक्षक्षितिपातिशामितम्

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

दनज्वरसुरसुंदरीजनगीयमान त्रिविधवीररसश्रवण जनितलज्जा
त्सरानमितमस्तकभावभवामनीकृतकल्पपादपश्री खरस्वकरसुरवा
वसितकुसुमगुंफितहारमंडितस्तनमंडलखुरकुंमारीपरिब प्रार्थि
तसकळकल्याणपरंपरः॥ गिरिदरीकुहर पलायन परायणसप
त्नजननिवेदितपंचाननाधिकपराक्रमः॥ प्रतीपमहीपतिमहिलाति
ळकांजनकटककेयूरकुंडलगलसूत्रंपाटच्चरतरवारिधाराविदा
रितवीरवारणतुरंगमक्रियरपरिमितरुधिरपूरबालारुण सार
थिप्रतापतरूणतरणिरागपराहततिरवधिपताकिनीराठ

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

द्भूत धूळि धोरणिसांद्र तमस्त्व तिरति वितत समरा ध्वरतर्पितभूतय
क्ष रक्षः पिशाच वेताळ डाकिनी शाकिनी कृत प्रचंड तांडव दुष्ट भैरव वर्गी
पमानावदानः। कुसुमतार सर्व स्वसुंदरी सहस्त्र परिवारशाली कृ
र्त्रिमान् शृंगार इव मुहुर्मुहुरुच्चारित गुंजा कलाप कुचक कल८रोत्थु॥
पलायित पौरनिकर सपल्लव पुर पतित विरल रत्न हार विनोद वि
न्यास संजात परस्पर हास विलास शासमान वनेचर विलासि
नीवदन वास वासना धावन्मधुकर निकर गुंजारव व्याजेन व
नदेवतागीयमान बाहु बलः॥ स्थापित राग रणाग्रकरुणाधिकरण

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

घर •नरपतिकळत्रकुमारः॥ प्रतीपन्हपाळकुळसंहारस्त्वक भ्रु
कुटिकेतुराकुरौऽवदनानुहृतकुपितकृतांतः॥ अन्निवेणिते परः
वातप्रतिभटश्रेणिकटक शरणागतकतिपयधरणीरमण• प्रचुर
तरधनयाचनसंगतयाचकजनविलोकनजनितपुलककर्दबकरं
बितसकळशरीरः शरीरवान्त्रिविधंवीररसइवत्रिविधः केसरिक
रिहक शार्दूळस्तकरकुळसंकीर्णन्हरुहजालभ्रपानक विंध्यागिरिकां
तारनिकरेषपिलयभरनिर्झरपरधरणिउजां एष्ठलग्नइवभास
मानः॥ प्रचुरवीरवारणतुरगनिकरप्रहरणदारितशरीरनिर्वदं

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

त्वमांसमेदोवसास्थिक्रूरसंकरघनेशोणिततरंगिणीविहरणलालस
वेताळभूतप्रेतपिशाचराक्षसकदंबवीक्षितसमररंगः॥ प्रतिनरप
तिनागरीनयननीरपूरणवर्द्धमानप्रतापदहनेनाद्भुतः॥ विन्यस्त
सकळसंगरांतहृदयसदयप्रतिमोदिनीरमणतपश्चरणशंकि
तनाकनायकः॥ सकलकलाकेलनकौतुकीकाव्यनाटकालंकारसा
हित्यसंगीतनीतिशास्त्राध्ययनधनुर्विद्यास्त्रचापचक्रबाणकृपाणश
क्तितोमरपरशुगदादिसकळप्रहरणेषुरथगजतुरंगारोहणस
चातुरीषु वीणावेणुपणवपटहकांस्यताळमृदंगदर्दुरप्रभृतिवाद्येषु

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

पुरुषलक्षणेषु चित्रकर्मसु दुरोदरकलासु ग्रह गणितेषु रत्नादिपरीक्षा
सु वास्तुविद्यासु वैद्ययंत्रप्रयोगेषु विषापहरणेषु सुरंगभेदेषु दुर्गा
रोहणगिरिविलंघनसागरतरणादिषु परराष्ट्रहरणेषु [illegible]पमच्छ
गयाविस्तारेषु सर्वलिपिषु सर्वदेशभाषासु सर्वसंज्ञासु कुशलः॥
कदाचन शास्त्रप्रसंगेन कदाचिदाख्यानकाख्यायिकेतिहास
श्रवणेन कदाचन गुणिजनप्रसंगेषु न कदाचन दर्शनागतविदग्ध
नपूजोत्सवेन कदाचिन्नीतिशास्त्रपरिशीलनेन कदाचिच्चित्रविनो
देन कदाचिन्मृगयारसकौतुकेन कदाचन चतुरतरुणीविलासर

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

१०

सिनकदाचिदविरतपरमेश्वरचरणस्मरणजनितपरमानंदसुधास
मुद्गलहरीविहरणसुखेननिरतिशयसौभाग्यमनेहसमतिवाहयन्ने
कः सार्वभौमः सर्वसमयसंपूर्णकळाधिकरणमपिद्वितीयः कलंकवि
कलः कुमुदिनीकांतइवस्वतंत्रस्तृतीयोनासत्यइवजळानभिभवनीयः
स्तुरीयः पावकइवनिरस्तभुजंगमकरः पंचमोरत्नाकरइवाकल्पि
तवितरणनिपुणः षष्ठः कल्पद्रुमइवापरिमितसत्वः सप्तमः शाकइवसर्वत्र
सर्वसमयगेयोमूर्तिमानष्टमः स्वरइवसपक्षः स्वैरचारीनवमः कुलाच
लइवसकळजननयनानंदनिदानंपरानधीनोदशमोनिधिरि

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

२

वनिःकंटकचतुरर्णववसनवसुमतीवलयसाम्राज्य[illegible]जनितहर्षप्रक
र्षःराजनमेकादशःपुरुषोत्तमावतार इव गजरथतुरगकनकमणिग
णभूषणदुकूलकुसुमचंदनसुंदरानेकमहिलादिलोकोत्तरभोगभो
क्ता द्वादशो महेश्वर इव दक्षिणायनगतोपि वर्द्धमानप्रतापमहिमान
वरतमहोदयस्त्रयोदशो दिनेश्वर इव कलितकार्मुकभुजप्रतापभ
ग्नानेकदुर्गाधिपश्चतुर्दशो मदन इव धीरसमीरसंगतरलक्षीरनी
रधिलहरीविहारिदरदलितनीलनीरजदलचपललोचनलीला
ळिनपसांगकुरंगनयनाजनन्वेत्य कौतुकविलोकनलालसश्च

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

नाना

रुद्रो विश्वावसुरिव नानाविध गुरुकवि कलाधन परिषत्पांडित्य परिशीलन
कौतुकी गोत्र परित्राणपरायणः पंचदशः पुरंदर इव निरवधिजाग्रदुग्र प्र
तापमहिमा पंचदशो मनुरिव वा धर्मकर्म परिपाळन समवलंबितावतारो
सौन्दर्य मीनोपि जलपराङ्मुखः प्रख्यातगुणकदंबकमठोपि परानपेक्षितक्षि
तिभरधारी वराहवरावतारोपि कंदर्पकोटिकमनीयमूर्तिर्नरसिंहोपि
समरपराजितप्रतिभटशरणः वामनगोत्रोपि शरणागतबळिनृपमो
चनकारी प्रचंडपरशुरामो दांतोप्यनवरतजननीहृदयानंददायी सुमि
त्रात्मजान्वितो रामोपि दंडकावनं गत्वा लंकानरपतिपरिग्रहहारी वसु

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

दिवजोपिनबलुकनिष्टः परद्रुःखकातरतयाबुद्धोपिनपाखंडमता
नुसारी वेदनघनसारकेसरस्तगमद्कंकोलकलितकलिवपुरपि
पवनकुलकमलविकासिनदिनमणिः दिल्लीपात्मापिनिजबलजित
पंचाननःरथुरपिनवेनोद्भवः नलोपिनकलिपराजितःविदुरोपिमाहा
साम्राज्यैपदवीविराजमानः ध्वनराजोपि छलोवनः कर्णवर्मानबा पि ५
णवकितःयुधिष्ठिरोपिदुरोदरव्यसनरहितः भीमसेनोपिगदाप
वर्जितःधनंजयोपिनमध्यमः सहदेवोपिनयमः समधिगतबकु
धामानकुलोपिनक[illegible]तिष्टःदुर्योधनोपिधर्मपरायणः महेभ्यरोपिन

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

विषमदृष्टिः हिरण्यगर्भोपि न विषमदृष्टिः हिरण्यगर्भोपि न क्षीद
सः विश्वक्सेनोपि न जनार्दनः सहस्रकरोपि न संतापकारी चन्द्रो
पि रोगान्न हृदयः चिंतामणिरपि न कठिनः अपरिमितपरिवारोप्य
द्वितीयः गजतुरगासाधनोपि खड्गैकसहायः एकदेशस्थितोपि रवि
रिव व्याप्तसकलभूमंडलः प्रशमितारोबहिर्विद्धिधनोपि ज्वलन्प्रता
पानलः आयतलोचनोपि सूक्ष्मदर्शनः सकलजगत्प्रासादशिख
रशेखरीभूतकीर्तिमहाध्वजः प्रचंडदोर्दंडमंडपमंडली विश्रांतज
यश्री विराजमानः किंबहुना सकलसौजन्यनिधि रीति बारबखानरख

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

नाम्निबवैरूपाकैः केनवर्णनीयः॥ जयत्ययेवजगत्ययेकचक्रवर्त्तिमहार
थः॥ प्रतापैकनिधिः श्रीमान्खान खानाख्य भास्करः॥१॥ वाहोलेखित
वेरिशोणितपयः संसिक्तसंग्रामभूनिक्षिप्ते नविदीर्णकुंभविगलन्मु
क्ताख्यबीजोद्गता॥ खानखानश्रीकमनीयकीर्त्तिलतिका रोषाहिमुक्तास्फु
रन्नक्षत्रप्रसवानिशाकरफलाग्रं गांमरंदस्फूर्तिः॥२॥ इदं प्रवृत्तिना
स्तिथीकृतसमानधर्मांतरं प्रचंडमहसाऽमुनाविवरदेकनेत्रंस्थितं॥
चिरं किमपिसंप्रति प्रबलखानखानप्रभोः प्रतापनवभानुनासमज
निद्विनेत्रं जगत्॥३॥ इदं त्वत्कथारूपाग्निः शामनकृद्दसिनानैकतिर्युहृक्र
केनैककूर्यणपश्चेतुनाः प्रहरपात्रयसा वाजिभोगेनवायकः॥४॥ अथ र-प्रास्या

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

कुबेरः प्रतिभटचरित क्रूरदृष्यामहेशः सेवंते स्वामश्रीनवाबंहरिदृधि
पतयोऽहंतसामंतकल्पाः॥४॥उल्लंघयेदपि पयोनिधि रेषवेलामिंदुर्दहेद
पिचलेदपि कांचनाद्रिः॥श्रीखानखानकलितालितालिता कदाचिन्नवान्य
थाखलुभवेदभयंकरोक्तिः॥५॥खानश्रीकमनीयकीर्त्तिमतुलांलोकत्र
यव्यापिनीं कैलासेनमहीभृता तुलयितुं धाता नवं सोद्यमः॥ तत्पृत्यैगि
रिशांततः शशिकलां पश्चात्तु मंदाकिनीं मांधायाप्यतुलेति नाथिनाक
नं विच्छोर्विवेशाद्रियां॥६॥धात किं ननु कुप्यते हि भवता सोऽहं ययाक
स्यवा श्रीखानेंद्रमहीपतेर्बतभवान्यव्यक्तो धुनावेदिकः॥कस्माद्यापज
गत्रयीमिदमसौकुत्रेति नज्ञायते धाता बाळसरस्वतीवचनतो न्नगो

घमो न्नूदत्तः ॥७॥ येनारातितमिस्त्र घर्ममहसा पाणौ ग्रहीता कधिभ्रा
म्यन्त ग्रथितो कृपाणलतिकाकीर्त्तिप्रतापो यमो ॥ सर्वोर्वीपतिचक्रचा
रुमुकुटालंकारचूडामणिर्खानक्षोणिपतिः क्षितौ विजयतामाचंद्र प्र
र्णर्णवं ॥८॥ ॥श्रीमन्नन्नबाबवैरखानखानायरिसो महाराजप्रताप
शाहाघोजितरुद्रकवींद्र रचिते प्रथमोल्लासः १ ॥श्रीमानुकल्पमरुद्दी
हः किमवनौ किंवा सचिंतामणिः किंकर्णः किमु विक्रमः किमथवा भोजोवतीर्णः पुन
इत्थं यत्रविलोकितेमतिमतां बुद्धिः समुज्जृंभते सोयं सप्रति खानखानन्नृपतिर्जीयाम्म
तां नृतये ॥१॥ खानाखानान्नबाबस्य गुणानगणयितुं विधिः ॥ तारामिषेण तनुते सु
धाबिंदूनलं पटे ॥२॥ मारोपि छूति पांथानि निपतत्त्क्षिते निपतत्कूजिते: सिंधवायवीर

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

॥न्नवत्करस्कपाणिक्राहतविपक्षपक्षोच्छलच्छिरःकमलसिंक्षिमाकुलसहस्त्रराक्षाकुलः॥सहस्त्रक्षि

॥णांस्फुरच्चुरगटापटक्रतुटद्धरातलत्वलद्गजःपटलपर्वतेलीयते॥९॥सुस्नातस्तरवारिवारिणिपुरो

॥धौतांबरंधारयन्सन्मंत्रंकलयन्परास्यकमलैर्न्देवतांपूजयन्॥जुद्धन्नेतदसूरप्रतापदहने

॥त्वद्बाहुर्विक्रम॥क्षत्रच्छत्रधैर्यदर्पयिवास्त्रांप्राणाहुतीराददे॥९॥एताःसंप्रतिगर्जगोरवञ्जरा

॥दीरावरोधांगनाःकांतारेषुपलायितुंबतकथंपद्भ्यांनवेषुःक्षमाः॥इत्यालोच्यनबाबवीरन्व

॥वतःसंग्रामनादीत्नवक्रेरीलाकृतिभिःसखीभिरविद्धितंक्रन्दपातःकृतः॥१०॥पलायितजनेन

॥वन्निशितबाणनिर्भूवलितप्रतीपनृपपतनेपतितहारमुक्ताप्रष्ठे॥नतिष्ठतिनरवोदरच्चपितकु

॥भिमुक्ताफलद्विपारिवसतिक्रमादपिक्षरातशातोदरी॥११॥नानुःप्रतापिभिरुदारयशोभिरिं

॥दुस्तातःप्रजाभिरिरिभिःकुपितःकृतांतः॥कल्पद्रुमोगुणिजनेमदनोंगनाभिःसंदीप्यतेजगतिभूपतिरवानरवाना॥१२

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

पे२ ता३

॥अथगद्य॥यत्रचराजनिराजनीतिचतुरेचतुरर्णवमेखलमेदिनीमंडलमखंडंशासतिविवादः
॥षट्दर्शनेषु॥सर्वमिथ्यावादोवेदांतेषु॥भेदवादस्तर्केषु॥अविद्याग्रंथान्यपूर्वमीमांसायास्पृ
॥टाविभ्रमोविद्याद्वैतेषु॥नास्तिकताचार्वाकेषु॥महापातकोपपातकश्रवणंधर्मशास्त्रेषु॥नयनाश्रूणि
॥हरिक्रियाश्रवणेषु॥छलजातिनिग्रहसंशयवितंडाहेत्वाभासप्रयोगःप्रमाणादिसूत्रेषु॥यतिर्वा
॥गोलक्षणवाक्यपदकृत्येषु॥मनसःपरमाणुत्वंतमीये॥उत्प्रेक्षाक्षेपोक्त्याद्यालंकारेषु॥कूटयुद्ध
॥मल्लाजारते॥नयप्रथमप्रियसमागमनीयमाननवोढवनितांतःकरणेषु॥काठिन्यंकृपाणटीकुचमंड
॥लेषु॥चापल्यंपाञ्चालीनयनांचलेषु॥मालिन्यंमालवीकुचाग्रेषु॥मात्सर्यंमरहट्टीषु॥कापट्यं
॥लाटीकुटिलकटाक्षेषु॥कौटिल्यंकेरलीकुंतलकलापेषु॥कार्पण्यंकाश्मीरकदंतदत्तेषु॥मांद्यंमागु
॥रीचलनचातुरीषुदंडःआभीरीकरकुसुमेषु॥रागोगूर्जरीबिंबाधरेषु॥धार्ष्ट्यंसौराष्ट्रीषु॥निःशंकं

व मी२

१३

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

स्वाधीनपतिकासु चिंताउत्कासु लोलुपता वासकसज्जासु पश्चात्तापः कलहांतरितासु आ
ग्रहो मानवतीषु नैःस्वास्थ्यं विप्रलब्धासु संतापः खंडितासु साहसमभिसारिकासु
दौर्बल्यं प्रोषितपतिकासु पराधीनत्वमनुकूलनायकेषु अनेकचित्ताराधकत्वं द
क्षिणनायकेषु कपटवादः धृष्टनायकेषु अपमानोपेक्षा शठनायकेषु द्विजिह्वता सर्पे
षु द्विजाघातः सुरतेषु स्पर्धा चंद्रकुरंगकामिनीवदननयनेषु अग्रहारपीडने
कांताकुचेषु रसनाबंधो रतिकलहेषु पाणिपीडनं विवाहेषु वर्णसंकरश्चित्रपटा
दिषु कन्याधिरोहणं सूर्यादिग्रहेषु खलसंसर्गो धान्येषु सूचीभेदो रत्नेषु वै
यं श्रीहरिबालचरित्रेषु भ्रमदविकारः कारीडेषु वनवारः कुरंगेषु पशुहिंसायोगे
षु श्रुतिविलंघनं ललनानयनेषु गोत्रभेदः स्वप्नेषु वैषम्यं मदनशरेषु हृद

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

दो १ तार कौ ३

यत्रै दाडिमीषु भ्रंखळा गिरिकपाटकरिचरणेषु बंधाश्चेत्रकवितेषु परिवादो वीणासु मूर्छागमो गानेषु कचग्रहः स्मरसमरेषु दंडः छत्रेषु कंपः पंकांचळेषु कलंकः शशांके इष्टबोत्सर्गः पिच्छकार्येषु दक्षिणवामकरणं दिग्विभ्रमयेषु सीरासेकायः कमळेषु मधुपत्वं भ्रमरेषु सुरालयत्वं सुमेरौ करवाल नाशो योधेषु अनेगत्वं मदनेषु रंगेषु करशाखिघातः सुस्वरत्वं नूपुरेषु परं व्यवस्थितं ॥ यस्य च मनसि धर्मेण तोषे धनदेन रोषे कृतांतेन प्रतापे तपनेन रूपे मदनेन करे कल्पद्रुमेण वदने सरस्वती प्रसादे न बळे मारुतेन प्रज्ञायां सुराचार्येण क्रीतौ वंडिकासमूहयेन स्थितं ॥ अथ गद्यं ॥ जयजयराजसमाजविलक्षणाविदलित दूषण गुणगण मंदिर मन्मथसुंदर चंदनशीतळशीलवशीकृतदुर्ग

१४

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

राश्यर   ५३

स्वाधीनपतिकासु चिंता ठकासु लोलुपता वासकसज्जासु पश्चात्तापः कलहांतरितासु आ
ग्रहो मानवतीषु नैष्ठ्यं विप्रलब्धासु संतापः खंडितासु साहसं अभिसारिकासु
दौर्बल्यं प्रोषितपतिकासु पराधीनं मनुकूल नायकेषु अनेकचित्ताराधकत्वं द
क्षिण नायकेषु कपटवादः षठनायकेषु अपमानो धृष्ट नायकेषु द्विजिह्वता सर्पे
षु द्विजाघातः सुरतेषु स्पर्धावैदकुरंग कामिनी वदन नयनेषु अग्रहारपीडने
कांताकुचेषु रसनाबंधो रतिकलहेषु पाणिपीडनं विवाहेषु वर्णसंकरश्चित्रपटा
दिषु कन्याधिरोहणं सूर्यादिग्रहेषु खलसंसर्गो धान्येषु सूचीलेदो रत्नेषु वै
यं श्रीहरिबालचरित्रेषु मदविकारः करीदेषु वनवारः कुरंगेषु पक्षहिंसायोगे
षु श्रुतिविलंघनं ललनानयनेषु गोत्रभेदः स्वप्नेषु वैषम्यं मदनशरेषु हृद

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

मदुर्गपरिग्रहविग्रहखंडितदुर्जनसज्जनरंजनराजविरोचनक्रमलवि
लोचनदुःखविमोचनपरदळशोचनशोणितवैरियशोभरसागरपरधरणी
पतिकुंजरगंजनसिंहकिशोरकठोरकृपाणनखाग्रविदारितवैरिन
राधिपमत्तमतंगजकुंभस्थलोद्भूतकीर्तिकिंदबकमौक्तिकहाराविभूषि
तभूमिवधूघनपीनतरोदयभूधरस्वरमावळमयकुचमंडलवीरधुरंध
रधरवलातिभवत्यरिपत्तनमुत्तमतावकघोटकखुरतटपाटितभूमित
टोत्थितधूलिसमूहमपोहितुमिव शत्रुकुरंगदृशः स्ववदंजनसंकुल
लोचनवारिकिरंति पंकरतुवदंतिनपिच्छिलितेपथिकंमिवाविध्याम
हीधरकाननवीथिपलायनकर्मभवे दिशिकिंचकुलाचलमंडितभू
धर॥

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

तुर

तळभूषण भुजबलनिर्जितभूमिपते। बलिशिबिविशिबिविक्रमकर्ण
सुपर्वमहीरुहौल्यमते। परदलभंजन कलिमलगंजन गुणिजनरंजन
धर्मरते। राजधुरंधर भूमिपुरंदर वैरिमगंदर सकलकलाधर धन्य
गते। चतुरशिरोमणि परमकृपालय पालय जलधिमिमे स्वकमवनीमं
डल मारविरिंद्र सलुई॥ अपिच मदन इव नागरीभिः तपन इव तपस्विभिर्द
हन इव मनस्विभिः शमन इव शत्रुभिः पवन इव पथिकैः स्वजन इव सुहृद्भि
र्जनक इव नागरैः सनक इव पारमार्थिकैः पार्थ इव धनुर्धरैः सार्थ इव
चारणार्थिभिः चिंतामणिरिव याचकैः चूडामणिरिव पार्थिवैः सुधाकर
इव लोकचकोरैः धराधरैः सुरिमयूरैः सागर इव धीरैः पुरंदर इव वै
इव

१५

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

वीरे रवक्रलो क्रितत्तथा नातिमांसल द्वात्रिंशदंगुलमिंत मुरवमंड
लं सप्तांगुल नतुतर निशिताग्रकर्णयुगुळं प्रचुरायत मृदुतरकेस
रं चामरित षडधिकपंचाशदंगुळमित कुंचितबंधुरकंधरं मुरवमानमितो
रःस्थळ कटितटोदरजंघं पीवरतर पश्चिमपार्श्वभागं पृथुतरपश्चिमे
डितं चामरचारुचिकुर सुंदर त्रिंशदंगुळलांगूलदंडं वर्तुलसप्तांगु
ळ खुरमनोहरं खुरादिककुदवधिचतुर्हस्तोत्सेधं लांगूलमूला
द्यपांगावधि पंचहस्तमितदैर्घ्यं मनर्घ्य स्वर्णावंडीशाकोदंडमिवाखंड
गुणमंडितं श्रीराममार्गणमिव दूषणासहनशीलं रत्नाकरमि
वं २

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

न:४ भ

वदेव मणिन्त्र वितं गं गात्रवाहमिव शोमानश्चआवर्तं महापुरुषमिव
सकळगतिवेदिनं राजानमिव चामर विराजितं जव विजित सुपर्णपव
ने [illegible] मनत सकुत्तमदेशीयमश्वराजमारूढस्त्वाहं गनेकतुरगा
रूढ महावीर परिवार विराजमानः सहस्त्रकगळदविरळमदजळमिल
दलिकुलकोलाहलकीर्मारितापरिमितमत्तमातंगसंघट्टहतरय
गर्वितहयहेषितरथचयचक्रचीत्कारगंभीरभेरीभांकारवारांगना
चरणमणिनूपुरझांकारचतुरवैतालिकजयजयकारव्रकुलुखकलक
लबधिरीकृतदिग्मंडलः सितहरितपीतलोहितविचित्रसामंतनृपध्वज
वसनविलसत्कटकमनोहरछत्रचामरमेघडंबरसुंदरैइतस्ततो
नूपुर दरसाहि ~~[illegible]~~
[illegible] जहांगिर नुरदीन महमुदर
नोकर सुधाकर ९ १८

28

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

वसंतोपशोभित घनतर मकरंदबिंदुबंदीकृतमिलिंदवृंदमेदुरमाकंदकु
रवकुरवककुरनकवीरेलतानिकरपरिरंभसंभ्रमलोलसमलयसमीरसे
वितपुरोपवनानिकमलकुलसमाकुलजलाशयपरलानि बहलकुल्या
पालितशालियवगोधूमादिहरितक्षेत्राणि च वीक्षमाणः सकौतुकैस
कलदिग्विजयकारी जयति श्रीनबाबजगतीपतिः ॥ धरणीधरत्व
चिकृतप्रयाणो धर्मे किमद्भुतमितस्त्र कलिः कृतयुगायते सुरपदायते मेदिनी स
हस्रकिरणायते भुजयुगं प्रतापोदयः ॥ यशो हि मकरायते गुणगणो नारा पि
यते सहस्रनयनायते नृपनबाबवीराग्रणीः ॥८॥ कीर्तिश्रीखानखानक्षि
तिपकुलमणेः प्रयास्यं बुराशिं किं कार्यं श्रीनिदेशः कथयकथयमयेतात
सिंधोजडात्मन ॥ नास्तीयदीनगण्यानतिविमलगुणान्मत्यनैर्मान्तुकाषीः

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

दे२

स्रा क्रोधान्मत्सपत्नीसदन विधुसा न्मा मसौयत्करोति ॥५॥ श्रीमत्रवानन
बाबूसैन्यजळधौ वं खत्कृपाणातडिद्दामिच्छन्न रिपुप्रतापतपनेनाराव
धारामुचि ॥ प्रणाइगोलिनवाहिनीसुरवधू कंदर्पदावानळः शांतो न द्दि
रराम वैरिवनिता सीमंतमागंदिय ॥३॥ श्रीखानखानक लिकर्ण नरेश्व
रण विद्वज्जनादिहनिवारितमादरण ॥ दारि द्यमाकल्पयतिस्म नितांतनीत
प्रत्यार्थि वीरधरणीपति मंडलानि ॥४॥ श्रीखानखानन्रपके सरीतुंगवे
नघारिप्रदांतिनिहते गुलिनांजनानां ॥ तत्कुंस्त मंडळ विदारण तूर्ण निर्य
त्सकीर्ति मौक्तिकचयेन दिशो विभांति ॥५॥ किंचित्रं वैरिललनो नय
नांजनहारिणः ॥ श्रीखानखानखड्गस्य हरणं रिपुसंपदां ॥६॥ स्नेहकोदंड

\30

व त्नुल्कहास्तविद्रारवश्रेणीसिरेणीदृत्राः साहाय्यस्य विकीर्षया किमु

नित्रिज प्राणेश्वराणां रणे ॥ क्षोणीकामनबाबवीरतिलकं दृष्ट्वा गवाक्षां

तरे श्रृंगारेण स पानकेन युगपद्विं दतिन्ना वांतरं ॥७९॥ नानादेशीय नाना

विध गजतुरगाद्योपहारानपारान्नित्यंपश्यन्न पाणां मुकुट माणिरुचि

स्फारितांघ्रि प्रसाराणां । उर्वीमाक्रम्य धर्मद्युतिरिव सकलामास्थितश्चक्रव

र्तीवीरः श्रीखानखानाजगतिविजयतां यावदर्केंदुबिंबं ॥८०॥ श्रीमत्ख

तापचाहो घोत्रिनरुद्रकवींद्रविरचिते श्रीनबाबखानखानागुणप्र

वर्णिते नं वंद्र प्रबंधे द्वितीयउल्लासः ॥ २ ॥ विधुन्मउळकत्पपादपवनं

विद्योतिवाग्देवतासुसंकेतायतनं नितांतकमलालीलाविलासायनं ॥

रि २ द्व २

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

धा।१

सर्वोप्रति व क्रत्नाग्य सदनं न्हू मंडली मं उनं । कीर्तैः के क्लिनिके न नं विजय
ते श्री खान खानान्न पः ॥ १५ ॥ खानन्श्री प्रबल प्रताप ग्नि खिनो नि:शेष मे
धा पते शात्रूणां पटक्कं त दीपम प क्रोजानामिध्र मापते ॥ मार्त्तंडांशुल सत्कृ
पाण लतिकाज्वालाकलापायते दारि ध्य प्रसरः सम प्रविदुषां स च पतंगा
यते ॥ १६ ॥ क्षोणी मंडन खान खानन्नृपते मालिः पटीर द्रुम स्तास्मिन्निर्गत को
ना खड्गमिषतो निर्मुक्त कुंचीनसः ॥ तत्प्राणिः कप मन्मथार्थिजनतासंताप
हारी तथा बैज्ञोपि ज्ञाति न्हमिपाक्ष निकर प्राणानिलानगीन्नवेत् ॥ १७ ॥ यो युद्धे
२ जातभानः सह च रौप्रितो नित्यमी घ्रजश्रीमोकंदात्रीमत श्रीशरविलगुणिज
नैर्मन्यते नम्यते मामायंन त्यजंति श्रिनगतण मनं प्र रूपहे को न वामः १८

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

न२

सो मं श्री [redacted] खानखान त्व मिव तव रिपु स्त्वत्र मोहे विरोध: ॥५॥ यदस्त्र
धाराधर दर्शनेऽपि प्रत्यर्थि पृथ्वीपति राजहंसा: ॥ दिवा: श्रयंते युधि
कांदिशीका: श्री खानखानान्नृपति: स जीयात् ॥६॥ श्रीखानखा
ना स्वप्नतापान्नमन्ये किंचिद्दूरं वसुधरायां ॥ यदेक मास्त्रित्य
विमुक्तसंघा: सर्वे रिपोदिकू तटमाश्रयंते ॥७॥ जयतनय नृपचक्रचू
डामणे सदाचार चातुर्य गांभीर्य वारां [redacted] निधे विनिर्जित्य विश्वंभरा
मंडलं श्रीमता हेमसत्तार दानोत्सवे कल्पिते मेरुशैलव्ययाशंक
याय घदाश्चर्य चर्याचमत्कार हेतोर [redacted] त्वदा कर्णपाकब्बर श्रीसुर
त्राण सुत्रामें [redacted] प्रियत्राण श्रीवीरनाथो निवासायाबंतावितानं
पुत्राग्य नुद्दीज हांगीर [redacted] शाह द्वितीय ॥१

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

चितेनेतिरोधानतानादविश्रांतमार्तंडबिंबप्रकाशादहोयामिनीका
लत्नोपस्त्रमादंगनामंडलीकांतविश्लेषवैयाकुलीमुक्तिहीतेतथा
चंद्रबिंबस्त्रवद्दुरिवक्रोपमेयंतपाचितपावीतत्रोत्तंपुरैवास्तवल्के
रवश्रेणीरंतर्न्नमद्दृगसंदर्सदंस्तेनकिंडुःखशात्यंबरीसर्त्कि
चर्कतिर्विंतांचकोरावली पंचबाणोपिचापंच नसंज्ञी वृरीकृति शा६
लज्ञाकुलःश्वेतस्तावल्लीडाकिनीशाकिनीचक्रवेतालमौलौपिंबा
दिनत्रैवरश्रेणयःक्वापियातास्तथावैरिस्तूपालवद्दूरिघोरांध
कारोपिविंध्यादिगर्तेषुसंलीयतेस्तूरपःकालनिर्णयेकग्रंथसं

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

दर्शमेके सुधामन्वते तन्वते केचन स्थानिवद्भावतो [illegible] यामि
नीकार्यमार्यास्तथा को कवं दंघनानंदमाविंदते पद्मिनीबाढमा
[illegible] मोदसंदोहमुत्साह ते रागत्रव क्षोणि न्वन्कीर्त्तिवत्ता रका कापि
नो ज्ञस्यते विश्वसंतापघातायघातापि ज्ञास्यद्रुवत्कीर्त्तये यदि
काबारुसाम्राज्यपट्टाभिषेके तु मीमांसते देवगंधर्वसिद्धास
रोयक्षरक्षोमनुष्योरगेंद्रादि जेगीयमानावदानप्रनन्तप्रता
पप्रस्तावप्रवीनप्रस्तोखवानखानक्षमापालसाम्राज्यमाकल्प
माकल्पतां ते॥२ जयजयचक्रवर्त्तिचक्रहीरघोरसंगरैकवीर
धीरहीरदानवीरवैरिकीर्त्तिधूलिनीरवाजिस्तग्नसिंधुतीर

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

यानरंहसा समीरं कीरसारिकादिगीतनीतिपालनप्रतीतसर्व
मेदिनीधुरीणविश्वरक्षणप्रवीणअंगवंगराठलाटगौडगौड
मेदपालखंजरीटकन्यकुब्जकीरसिंधुसूरसेनसत्रपार
मल्लवालचोलमालवादिनेकदेशशासनधुरंदिपेल्लोकमध्यलो
मो ८६ कनामलोकगीयमानकीर्तिहूरपुंडरीककलहूरराजमौदिकुंकु न५
रंगलोचनाविनोदभावमानस[illegible]साहिराज्यरत्नसं
त्फलोपधाननासमानुपन्ननोनबाबरखानखानराजहीरधारवीरजी
वजीवमेदिनीदयावर्द्दिगजमदराक्षितारकासमुद्रचंद्रभास्करे॥ ॥
जयपुतिमधुरस्तोत्रविश्वविख्यातकीर्तिः समरहतविपक्षः सर्वविद्यासु

द्वितीनन्नरदीन४

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

रवा

द्दौः॥ वितरणजितकर्णः पालिताशेषवर्णः सकलनृपतिहीरः षौनषा
नाख्यवीरः॥१॥ सप्तर्षिद्युतिभृत्सुरप्रियकरः सप्ताश्वसेवापरः सप्तद्वीपवि
हारिकीर्त्तिनिकरः सप्तांगराज्येश्वरः॥ सप्तांभोधिविभूषितक्षितिप
तिः सप्तस्वरज्ञानवान्सप्तार्षिः प्रतिमः क्षितौ विजयते श्री षौनषानान्
पः॥२॥ नबाबनृपतेरुत्कटकचोटकप्रोत्कटस्फुटखुरतटत्रुटद्धरणि
पृष्ठरेणूत्कटः॥ अर्द्धकितटिनीविटस्फुरविपाटनप्रोद्भटः सुरैः स्वत
टिनीनटत्कटकवाटपाटवपरः॥३॥ श्रीमन्नृपसमूहभूषणमणिर्नृदे
वचिंतामणिः संग्रामार्णवतारणैकतरणिस्तोजोदुतारिणि॥ ६

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

द्यो कीर्त्तिर्वदान्यैतैक सरणिर्वागवृद्ध्य श्रीसारणिर्जीयाद्वीरतमिस्त्ववा
सरमणिः श्रीखानखानोगुली ॥४॥ आरापर्णविराजितं गृहगणज्ञा
ळेयस्थैराश्चितं दिकुञ्जिक्रमरावलीवलयितं गीगामरन्दाकुंतो ॥ हेमछ्मा
णिकं धरकैसरैरपरिल सस्तयैदुहंसद्वयं यावद्भिस्सरोरुहं विजयते त्वंवी
र तावज्जय ॥५॥ वीरा खेडळ खानखानजगती भर्तुर्गुणैर्गुंफिता सोदामो
दमिळत्प्रतापनृपतिप्रेमा स्मतेस्यादिनो ॥ विद्वन्मंडळचचरीकपरिषव्द्वे त्थ
मत्कारिणी वाक्स्तानकमालिका मतिमतां कंठे विभूषायतां ॥६॥ रा
केन्दोर्गिततियोसौम्यैवैराम्बवेळक्लृपद्वतौ ॥ चरित्रं खानखानस्य वर्णितं रुद्रसूरिणा ॥७॥

38

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

पुरंदरप्रताप

.नार

नैसवनिरवानरवानन्दपत्रेओगौवदेवाचर ॥ २॥ सकळगुणपरीक्ष
पैकसीमानरपतिमध्ये वंदनीयधामा॥ जपतिजगतिगीयमानधामा
गरिबनिवाजनबाकरवानेरवाना ॥ ३॥ बलिनृपबैधनविक्रमोर्जितः
श्रीखानरवानाइयं ॥ ३ बिरदंवरमदनौतनयो ॥ दानोचिताने दराबो
४॥ वीरश्रीजहंगीरसाहिमदनग्रोठगतावोदयदैत्यदक्षिणदिकुरंग
नयनासंसर्गसक्रोतमिता दौणीमंठनखानरवान आरती पाळेतदीयोबरं
व्याहोपायकरंवितन्वतितयासानंदयालूयने ॥ ५ ॥

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

श्रीमन्महाराजाधिराज श्रीकबाबखानखानानुज्ञद्विजेन्द्री शाकामयस्ता
डि पुरंदर प्रतापशाही योजित रुद्रकवीन्द्र विरचिते दत्तीये [illegible]
सः॥ ॥ त्वद्दोर्दंडब लोपजीवक त्याज्यामेव यो नाथ [illegible]
णवर पद्मप्रकणा नगु हिंपदमपोद्भूते॥ दूर स्थोपि वयस्यावेव परिभूय
स्वाति माप्पानते सो र्मना हतुरखाने स्थान भवतः श्री [illegible] पः कपंचा॥
पवृवीरपदेष पुत्रपदवीनाक्रो पितः श्रीमता पयो कबर सा [illegible] धिवम
तो॥ २ तेरन्नीन [illegible] द्विजो सो दैनमुद्दानवा बवर णानगा गः प्रताप पुनर्य

KKSU LIBRARY
RAMTEK
441 106
M-1480
Dist. Nagpur

140

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

[OrderDescription]
,CREATED=16.10.20 15:44
,TRANSFERRED=2020/10/16 at 15:50:30
,PAGES=40
,TYPE=STD
,NAME=S0004059
,Book Name=M-1480-NABABKHANKHANACHARIT
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF
,FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection

FILE19=00000019.TIF
,FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF
,FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,FILE33=00000033.TIF
,FILE34=00000034.TIF
,FILE35=00000035.TIF
,FILE36=00000036.TIF
,FILE37=00000037.TIF
,FILE38=00000038.TIF
,FILE39=00000039.TIF
,FILE40=00000040.TIF
,

CC-0. In Public Domain.Kavikulguru Kalidas Sanskrit University Ramtek Collection